
कविकुलगुरू - कालिदास - संस्कृत - विश्वविद्यालयः

॥ श्रीगणेशाय नमः ॥ ॥ श्रीसारदायै नमः ॥ ॥ श्रीधन्वंतराय नमः ॥ ॥ स्फुरच्छ्रि(?)तस्फुंदरीचरणाम्बुज्म
माराध्यानू प्रणम्य च रुजां हिं प्रथम खेद्य मंत्रोधिजं ॥ १ विलोक्य विविधागमान् करणवीर कं नात्मजः ॥ श्वि
किसितमतं निजां प्रथयंती दुर्गडं विद्या म कारणमंडल वितते लक्ष्मरथे जेषजोद्योतं ॥ ज्वरतिमिरभास्क
राख्यं ग्रंथं तनुते सरोगिणं स्वास्थं ॥ २ संति यद्यपि तंत्राणि सुविस्तीर्णान्यनेकशः ॥ तथापि बालबोधाय सा
रमुद्धृत्य लिख्यते ॥ लक्षणे ॥ धन्वंतरः प्रश्नेन रोगाणां ज्वरश्चिकि सितमन्यथा ॥ तस्मात्तस्यनामादि चिकित्साक्रम
उच्यते ॥ ४ ॥ दक्षयमान संक्रुद्ध रुद्रेष्र्ध नयनोद्भवः ॥ आसीद्दक्षाध्वरध्वंसी वीरतत्र [illegible] विभोगणः ॥ ५ ॥
त्रिमौलिः त्रिनयनो ज्वालासदृशमूर्द्धजः ॥ विपादस्त्रस्मप्रहरणः ॥ स्फुज्ञानवलोव
नः ॥ ६ ॥ व्याघ्र चर्म परीधानो ह्रस्वजंघो महोदरः ॥ हविजीर्षी कृतं तेन तेन ज्वरस्तिस्मृतः ॥ ७ ज्वरो
रोगपतिः पाप्मा मृत्यु राजो सनो तकः ॥ क्रोधो दक्ष [illegible] ध्वंसी ॥ सर्वभूतप्रतापनः ॥ ८ एवमानामानि
ज्वरो नानायोनिषु वर्तते ॥ ज्वरं विद्यान्मनुष्येषु ॥ कुंजरेषु अपाकलं ॥ ९ महिषीषु च हारिद्रं ॥ करस्तेषु बल
संतथा ॥ उरगमेषु तापाख्यं ॥ जानीयाज्जीषु चेत्करं ॥ १० खरेषु खोरकं सर्वो मत्स्येष्विंद्रमदं तथा ॥ यत्रुपातं वि
हंगमेषु ॥ अलेपक मजा दिषु ॥ ११ [illegible] तुतुविराधा ॥ श्मपंचानन ॥ शिवाल्तदमद्राश्च ॥ मृगष्वेवमृगा
नयं ॥ १२ अलर्कं सारमयेषु ॥ [illegible] ईकपद सर्पिकं ॥ उष्मी [illegible] विनिर्दिशेत ॥ १३ ॥

Title → ज्वरतिमिरभास्कर (अपूर्ण)
Author → कायस्थ चामुण्ड
Date → ?
Subject → medicine (औषध)
folioes → 16
Xerox pages → 32
Acc. No. → ~~1463~~ M 1394.

①

नेत्ररोगांतं । तद्वद्द्वेष्ठकोटरं । पक्वात् लक्षणसूत्रं च । तद्वद [illegible] का ॥ [illegible] ॥ [illegible] माख्यं च । नीलकां

सलिके [illegible] सर्वेषाधिष्ठ ज्यातिष्कं । लतास्तु संधिकं तथा ॥ १६ ॥ अथ रोदात्र नमीष्ठा । पर्वतेषु जिलाजतु । प

वीसंसंप्रसूतेष्ठा । ना आक विद्यान्मधुसूपकं ॥ १७ ॥ इति [illegible] मानि ॥ छ ॥ ॥ तस्य प्रवृत्ति दृष्टा । दोषाः स

रीरमानसाः । शरीरं नहि निर्दोषं । ज्वरः सर्वप्रसव [illegible] ॥ १ ॥ जन्मादौ निधनं चैव । प्रयोवशाति । ददिनां । संता

मरुचिं च । मंगमर्दं मुखे व्यथा ॥ १९ ॥ सकरो निस्वस्ता   [illegible] जनकध्यातारः । तादवे मनुष्ये

स्यो । नान्यो विषहे ज्वर ॥ २० ॥ प्रभाव दृष्ट्या दोषे   [illegible] समासतः । आगंतुश्च मलास्तत्र

स्वैः स्वैः प्रकोपणैः ॥ २१ ॥ आमाशयप्रवन्नपा   मामन्तुगम्य विक्षयत्व । श्रोतांसि पक्तिस्थ ।

नाद्य । निरस्य पक्तलनं बहिः ॥ २२ ॥ सदाततनान्ति सर्पति   सर्पन्तः सकलं वपुः । ऊर्द्धताता गात्रमत्युष्णं

रं निवर्त्तयंति ता ॥ २३ ॥ आता विभ्रधा प्रायेण । ततस्वे   दानजायत । निदानकारणान्यष्टौ । यान्युक्तानि

महर्षिभिः ॥ २४ ॥ स्वे स्वे स्थाने प्रकुपितानि यास्यंति [illegible] ताम्य [illegible] । मिथ्या [illegible] रपि वा । स्नेहाद्यैः कर्म्मेति

[illegible] ॥ २५ ॥ विविधादपि घाताद्य । रोगास्छानात्मपाकिमः । श्रमात् [illegible] यादीजीर्णाद्व । विशात्सात्म्य [illegible]

ता ॥ २६ ॥ अषधी [illegible] गंधश्च । कोपान् [illegible] पीडया । [illegible] चारात्तिता पा [illegible] मनोत्तता । [illegible] कया ॥ २७ ॥

स्त्रीणमपप्रजातानां । [illegible] प्रजातानां नं तथा द्वितैः । स्तन्यावतरणे चैव । ज्वरे दोषैः प्रवर्त्तिता ॥ २८ ॥ श्रमोर

२

लि विवर्णत्वं ॥ वैरस्यं नयनप्लवः ॥ इच्छाद्वेषौ मुहुश्चापि शीतवातातपादिषु ॥ १९ जृंभांगमर्दो गुरुता रोमहर्षोऽरुचि
स्तमः ॥ अप्रहर्षश्च शीतं च भवत्युत्पित्सति ज्वरे ॥ २० तस्याचांतरात्तदास्यामुक्तिकालोथतस्यती लक्षणं ज्वरमुक्तस्य ॥
क्रमशोऽत्र निगद्यते ॥ २१ शारीरो मानसः सौम्यस्तीक्ष्णः प्राकृतवैकृतो ॥ बाह्यांतरवेगंकोसाध्यसाध्यस्तु विपाकि
नो ॥ २२ साध्यासाध्येतथ्य सामापच्यमानो निरामकः ॥ शारीरं वपुषस्तापं ॥ मानसस्तप्यते मनः ॥ २३ मडलुपर्द्दवः
सौम्यास्तीक्ष्णस्याद्विपर्ययात् ॥ वर्षाशरद्वसंतषुवाता द्विप्राकृतः क्रमात् ॥ २४ वैकृतोऽन्यः स च साध्यः प्राक्
तः श्वानिलोद्भवः ॥ बहिर्वेगस्यचिह्नानि संतापोऽभ्यधि काबहिः ॥ २५ तृष्णामार्दवंच चडादाना ॥ सुखसाध्यत्वमस्य
च ॥ अंतर्वेगोतिदाहार्तः प्रलापश्वाससंकुलः ॥ २६ स शूलमप्तवदो दोषवर्चोविनिग्रहः ॥ दोषप्र
कृत्युबलादीपन्नमदनान्नरा ॥ २७ इंद्रियाणातया नेत्रामडुत्तसुखसाध्यता ॥ अनुपाकीज्वरेश्वासा
हृन्नाशोखदनाररतिः ॥ २८ तीव्रताराति सारश्च ॥ तामा राचकावपिस्यामज्वरे स्यादल्पानिद्रारायवतीद्रण
ता ॥ २९ हृद्रुता सार्बजमस्तवंचानपद्दतिविशोस्तचि ॥ पच्यमानज्वरचिह्नं ॥ ज्वरवेगाधिकं तृषा ॥ ३० मलप्रवृत्ति
रुत्क्लेदः प्रलापः श्वसनं भ्रमः ॥ निरामज्वरगात्रलघुतां ज्वरमार्द्दवं ॥ ३१ दोषप्रवृत्तिरुत्साहः क्षुत्क्षामत्वं च
जायते ॥ साध्येत्वुपद्रवो दोषपाकस्यादल्पलिंगकः ॥ ३२ असाध्योपक्वपाकी यद्द्वसंयुतः ॥ ज्वरस्यमो
क्षकाल आश्वासा विज्ञेद हृन्नान ॥ ३३ स्वेदो विसंज्ञता कंपो ॥ वेगंधश्चाति हृदुभ्रमाः ॥ त्रिदोषज्वरेलोता दंतवैरा

3

शश्वत्तजे॥४४ म्रियमाणः इवेद्देत। चान्यस्मिन् स्वेददर्शनं। नात्राकाले दरीयति। दोषाद्दीणेपि विक्रमं॥४५ निर्वीण
कालेदीपस्य। प्रज्वलत्यधिकं शिखा। ज्वरस्य केंगितं ज्ञेयं। पश्चेदो मुखपागतो॥४६ अत्राकांक्षा शिरकंडू। स्वथु
गौरवलाघवं॥छ॥ ज्वरारिष्टानि॥ ॥ ज्वरोनिद्रंतिबलवान्। गंभीरादीर्घरात्रिकः। सप्रलापभ्रमश्वासः। क्षीण
शूलंहतानलं॥४ विसज्ञस्ताम्यातयस्तु शान ति तीति विवा। शीतार्दितातदस्मस्था ज्वरेण म्रियातनरः॥ रक्त
ज्ञाः सीमंति। नायस म्ं द्विसेविनातक तो चादिपक्ष्माणि तं ज्वरोहंतिमानवं॥ य्योहृष्टरोमरक्ता
क्षोहृदि सं वान्। वक्त्रेणैवोरु तो ज्व रोहंति च मानवं॥४ हिक्काश्वासतृष्णायुक्तं मूढं वि
भ्रांतलोचनं। संततोच्छ्वसितं क्षीणं। न च तिज्वरः॥५ आरंभाद्विषयोयस्तु शीघ्रमेंद्रियनो
ग्राहत्वा हतश्चंत्रीव्वरवमं ज्वरं सारयातनरं॥ चात्रतीसारोज्वरोहिक्का॥ ब्रह्दिः शिलाग्रेदनं।
कासिनः श्वासिनश्चा यस्यतक्षीणमादिशेत्॥ ॥सद्गसाद्द्वरसंताप। स्तृष्णामूर्छाबलक्षयाः। विश्लेषण
वसंधीनां। वेगार्तश्चपरिस्यनेत्॥७ नेत्रनीलाकृणपीता कंवस्तु नजीव। तज्वराशीस्तु। यस्यलपानी
हत्रां॥ पत्रजन्मू विध्वजस्वासी मारा चकपीडितः। हृतेंद्विपोमसुखस्या सजत्रीध्रजशत्प्स्यन्नू॥ अन्नसेदिव
सेनारी॥ ज्वरातिविष्यमानुयात्। सात्रज्ञाविमदाप्रात्रः। यस्यातिसरणंलावत्॥२ ज्वरः स्वर्वान्तिको यस्या शुकंकासस्थ
दारुणः॥ बलमांसविहीनस्य। यथाप्रेतस्तघिवस॥२ गात्रसाग्विदनाग्रस्या श्वेदः प्रच्यवतस्तदा। लेपज्वरोपसृष्टस्तु।

२

डुर्लभं तस्य जीवितं ॥१४॥ स्वेदो ललाटे हिमवान्न यस्यासीद्धि सिद्धे तिस्र पिच्छलस्या कंठ क्लिन्नो यस्य न याति विद्धो न्नूनं यमस्ये
तिथिर्हं समर्त्यां ॥१५॥ अतः स्वेदो ललाटस्यास्य सवांबुबंधिनः छिद्यते उच्छ्वासमानस्तु । सम्यलोपि न जीवति ॥१६॥ यस्य स्वे
दो तिबहुलः । पिच्छलो याति सर्वतः । रोगिणः सर्वगात्रेषु । तदा मरणमादिशेत् ॥१७॥ दाघः क्लमा गरुसदनं जडता
तिवेगो । मूर्छा स [illegible] वेदन निश्वासितं च मिश्रा । हिक्का रतिर्निश निशाशायनं हि यस्या देते त्रयो दशान रेकिलम्नं
कामा ॥१८॥ सम्यक् चिकित्स्यमानस्य । विकारो यो निवर्द्ध [illegible] ता । प्रदहि एष बलं मांसा क्षल्लकी ण तद्धताद्युषः ॥१९॥
प्रेत न्नूतपिशा वाद्या रक्षो सि विविधान्निचा मरणालि [illegible] सुखं नित्यमुपसर्प्यति मानवं ॥२०॥ निनेषजन्य
या ऐश्रतिघ्नं ति जिघांसिया । तस्मान्मोघाः क्रि [illegible] यः सर्वी न्नवत्येव गताद्युषं ॥२१॥ ॥उक्तं च ॥ ॥
॥ गेणेष्वेव बद्धात्पाङ । श्वासा तं कारयेक्ति [illegible] विदैवसंयोगा । हष्टहष्टो पि जीवति ॥२२॥ काहति
नारिष्टानि ॥ ॥इति श्री कायस्थ चामुंडकृतं [illegible] मिरत्नाकर रहस्य भेदनाम प्रथमोध्यायः ॥छ॥ ॥१॥
गद्यं ॥ ॥ दृढं वस्त्र सरलं हस्तं । स्वानाडी परीक्षयेत् । करस्यांगुष्ठमूले या । धमनी जीवसाक्षिणी ॥१ वहते वायु
मद्ये ॥ पित्त श्लेष्मा निलैकमात् । शीघ्रमंदाति वक्रा च । क्रमाच्चांगुलिपीडिता ॥२ मिश्रा द्वंद्वजा ज्ञेया । संनिपा
ते त्रिसर्वगा । नराणां दक्षिणे हस्ते । स्त्रीणां वाम विलोकयेत् ॥३ उद्वेग क्रोध कामेषु । भय चिंतोदये तथा । तस्मा त्रायि
गतिर्नाडी । न्नवत्येव न संशयः ॥४॥ अति क्षीणा गतिर्यस्या । अति शीतास्वया न्नवेत् । न सा नाडी न्नवत्ज्ञया । मत्कुंडल

पित्ताढ्यके ॥ पश्चात्संस्थानं चलितं ॥ यावद्गाढं न लेपिकं । तद्दृश्य दिशायाति । नाडी तत्फलं भयंकरी ॥ ८ प्रातर्नाटिको ॥ ॥
रोगिणं कारयेत्स्नानं प्रातस्तन्मध्यमं नयेत् । श्वेतकाचमये पात्रे । परीक्षेत पण्डितः ॥ ७ वातनीला सुरारुक्षा । पित्ते
पीतातिलोहितं स्निग्धं सीतं घनं स्थलं कफे । मूत्रं श्लेष्मप्रकोपजं ॥ ८ मिश्रितं द्वंद्वजं ज्ञेयं । दृष्टं सान्निपातिकं । याम्यदिक्कोणतोन्य
त्राच्छिन्नं दं तैलदर्पणं ॥ ९ अल्ला मृत प्रेता दोवेद्भूवा । व्योमिटयन्त्रो । मात्रजः पूर्वादिक्क्रमादोषास्तैलबिंदुप्रसर्पणे
ता ॥ १० चालिनी सद्दृशो प्रेत । त्रिकोणे शाकिनीमताञ्ज   लदेवीनराकारे । केवलं मद्यपश्चात् ॥ ११ अंजीर्णमलव
श्च । तिलतिष्ठति । बद्धवत् न मज्जति यदा ... च   माध्यानैव सर्प्पति ॥ १२ तदा रिहिं रोगिणो ज्ञानीयात्
च्छत्रशाय ॥ प्रासाद चामरं छत्रं । पताका हंस ॥   हस्तिनां ॥ १३ हयवाजिसरोजानां । साकाराश्छत्र
स्वकाः ॥ शृगाल हल कूर्म्मी दिग्नुनायरवलेरदं   छिन्नं ॥ १४ काकोलूकटंकलसानां । साकारान्तत्फलं
तकाः ॥ एकादिमार्गानानारूं । विनारकोनरोधवा ॥ १५ ॥   हरूपातवाऽचलीयेत । तैलतपरिविज्ञायत । क्षाराद्वे
तन्मूत्ताज्ञेया । पीतक्षारतदाह्वरं । दीर्घरोगप्रदारक्ता । कृष्णान्तत्फलं भयंकरी ॥ १६ प्रातिमूत्रपरीक्षा ॥ ॥ उदङ्मुखे
प्राङ्मुखे वा । निवातेनिलये हरी । गुरुः समसिचयेः शय्यां । क्षतेपाकुविरसंचयेत् ॥ १७ नवम्हफजनेकाग्यां यथादे
यंजलंततः । शीतांकृत्वा उपेयांस्या दनाघा शोषदाहदं ॥ १८ तरुणे ज्वरे प्राज्ञ । ऋषिः सप्तदिनावधिमध्यं वाद २
शाराष्टं उराणमतउन्तरं ॥ २० तरुणे तिक्त रवर्या । कोष्ठसंदानु च शीतलं । परिवेकाथ गाढाश्चस्नेहः संशोधनं ॥

निचा॥ २४ स्नानाभ्यंगदिवास्वप्नाञ्शीतव्यायामयोषितः॥ कषायगुरुरूक्षाणि विशेषेण नवान्नकं॥ २५ नवज्वरनवस्थि
तदोषाये॥ रत्निः संक्षुभिता ज्वरः गंभीरतीव्रां वगित्वा यात्यसाध्यत्वमेव वा॥ २६ ज्वरोष्मः छर्दिर्मूर्दाहमूर्छाज्वरस्तृष्णा
तथारुचिः श्रान्तोस्तुयध्वानतान्॥ क्रोधादिनातिसेवनात्॥ २७ श्रमीरायस्तो हव्याग्निः सामामाशयोन्नु पिक्षययत्
विदधति ज्वरं दोषा स्तस्मात्कुर्वीत लंघनं॥ २८ प्राणाविराधनादेवान् लंघनानापपादयत् बलाधिष्टानमारो
ग्यं तदर्थेयं क्रियाक्रमः॥ २९ श्रामनन्नुस्मानदोषो छन्नं नविपच्यातात्स्मादेदोषपचना ज्वरितानुपवा
सयेत्॥ ३० नजीर्यत्यौषधं यस्मा ज्वरात्तस्य विमाङ्गिना॥ तस्मान्न दद्यात्भेषज्यं लंघनं तु प्रयोजयेत्॥ ३१
॥ वयोदोषबलं कालं प्रकृतीः करणं तथा॥ विचा र्यलंघनं कार्यं ज्वरितस्यद्वरापदा॥ ३२ प्राग्
रूपं चातवह्निर्दोषानाय च तिलंघनं दोषे वृद्धि नाप्स उष्णप्रणांस्तेषां हायन्तरणा॥ ३३ एकरात्रं त्रिरा
त्रं वा पंचरात्रमथापि वा॥ सप्तरात्रं नवश्यमाः निराहारका दिशायिवा॥ ३४ लंघनस्यहतः कालो॥ दो
षरूपानुसारतः॥ दोषाणामवसा शक्तिः र्लंघनया साहिष्णुता॥ ३५ न तु दोषत्रयेकस्मिं सहते लंघनादिकं॥
सप्ताहेन तु पच्यंत सप्तधातुगतामलाः॥ ३६ निरामश्चाप्यः तदप्रोक्तो॥ ज्वरः प्रायेष्टमेहनिः॥ जीर्णतामवियर्य
सान्नुसप्तरात्रं चलंघनात्॥ ३७ लंघनं मात्रया कार्यं सामती जेकफ ज्वरे॥ मतीसारप्यजीर्णे च कार्यं वा दोष
बलाबलं॥ ३८ प्रनलंघयेनिरामंतु ज्वरणं क्षीणादू वातिनं॥ बालं वृद्धं स्त्रीं क्षीणं तृष्णातुरमतिक्षुधा॥ ३९ वर्तिणी

क्षुद्भ्रमार्त्तस्त्रीरमूर्छा निर्लज्जनं कामक्रोधस्तथाघातात् ॥ वृत्तली तिग्मवान्धोरान् ॥ अन्तसराउक्ताः सर्वे लंघनेन क्षयं न
यत्ताल्लंघनैः क्षिपितादाबादी मर्मोलाघावसती ॥ अथ स्वस्थमुत्ते इन्द्रुस्त्विः एकिबलिसो अप्यजायत ॥ स्वलं घितेनर
विंद्यात् क्षुत्पिपासासहं लघु ॥ अथ कष्टमारुतविण्मूत्रं क्षामं प्रसन्नकं इन्द्रियं स्वान्मध्वलं घितबाक्षा ॥ विट्
बंधस्वक्वेतारुचि ॥ अथ गतक्लमरुजास्ता निर्दिनिर्वे इन्द्रियाणां प्रसन्नता ॥ अतिलंघनात्साध्या ॥ ब्रतवत्य
धुपद्रवा ॥ ४ रतद्वा ॥ मेढ्यात्रमात्रा ॥ निद्रस्या दोषबलक्षया ॥ ॥ इति कायस्थ राघवदासतनुजरतिमिरभास्करे
नाटिका ... ॥ मद्वितीयाध्यायः ॥ ॥ २ ॥ ॥ मधुरम्लं घृदेहे ॥ अचलघुमले ... चाएकदो
षं विजानीयात् ॥ तदा दयं हितो षष्ठः ॥ रसमात् दोषं के चित्प्राज्ञ रसपेद वाहृते ॥ के चिन्न
धुंनंतुजीतो कस्या ॥ योज्पश्मास्मोल्वणेनवा ॥ अतिक्त पितहारादयः ॥ कटुकाः कफनाशनाः ॥ पित्तश्ले
ष्महरो लेपः ॥ कषायो नवरो रसः ॥ इनवद्धातुमलक्ष्मं नीलाविषमता ब्वरा ॥ हृल्लासमभक्तचिद्विक्षा ॥ कषा
यो जनलयद्रसः ॥ ४ ये भाषायामरुत्पित्ते वसंतकफमारुते ॥ मरुतं योगवाहित्वात् कफपित्तेतु तारदः ॥ ५ ॥
क्राथस्सप्तविधः प्रोक्तः ॥ पाचनः शमनः स्ताधा दीपनः क्लोदनो भेदी ॥ संतर्पणे विशोषणः ॥ इयाचनो घृविशो
धीस्यात् ॥ शोधनो द्वादशांशकः ॥ क्लेदनश्च तुर्थांशः ॥ शमनश्चाष्टमोमितः ॥ तर्पणी पादशेषः स्यात् ॥ तर्पणश्च स
मांशकः ॥ विशोषी षोडशांशः स्यात् ॥ कनःकाथनक्रो सत्यता ॥ ६ पाचनाय च ताद् ॥ दीपनो दीपनतलं शोध

४

नोमलज्ञोभ्रीस्यात्॥ यामन: शामयेद्दत्याय्यायुनमणि सर्पिनेध्मन्तन्॥ केदीहूक्षेदकारक:॥ विशोषीशोषमाश्वेतां ज्ञा
ज्ञाकालंनियोजयेत्॥ १० निराश्रयाचरनादयः॥ कृर्वीक्षेशामनस्तथा॥ दीपनोपाचपराक्तोउ॥ कल्पेत र्प्पणेदनो॥ ११ मत्रेना
तेज्ञोख्णोदद्यात्॥ केदस्वार्धरात्रिकात स्मात्रादोप्रदेयंउ॥ पाचनंउदिनत्रयं॥ १२ शामनीयंचप्रदेयंउ॥ पंच
रात्रांतथोपरि॥ शोधनंदीपनीयंच॥ एकरात्रोप्रक्षपयेत्॥ १३ काथ्यपानेत्क्रमस्त्रुर्षी॥ विकल्पंवाप्रहृदयतावम
नंचतदाप्रोक्तं॥ शामनंपच्यकोपिवा॥ १४ उत्तमस्यफलंमा त्रा॥ मध्यमस्यपिचंत्रयं॥ जघनस्यपलार्द्धस्यात्स्ने
हक्वाथोष्वेशुत्रा॥ १५ चतुर्गुणंम्प्रदोद्रव्यो कर्तिनेष्टः गुणांजलं॥ कल्पिनाकविनादयं॥ व्रोक्षेपोडश
कंतथा॥ १६ अन्तौउप्रमाणंस्यान्मृद्वादिद्रव्य संदतो॥ जलमष्टगुणंदयं॥ प्रयंसाक्षरणे
विधि॥ १७ ...कंचारंगुग्गुलंचारोला॥ जि उ॥ हिंगुत्रिकटुकंक्वाथे प्रक्षिपेमाणमात्र
कं॥ १८ घृततैलमं...दीरं॥ मात्रंकमाचकादिसाहर्ष कल्कादिकक्वाथे॥ कर्षमात्रंउनिक्षिपेत्॥ १९
चउर्नीगावत्रिष्टंवा प्यष्टमागावशिष्टकं॥ वायादोषमघाश्रादीन्दा वीक्षमात्रांप्रकल्पयेत्॥ २० घृतंतैलं
चपानीयं॥ कषायंव्यंजनादिकं॥ पक्कारीतिउनस्तप्से॥ सर्वेतत्पाविशोपमं॥ २१ नोलंघयेतघृतंक्वाथं॥ ख्लनात्
न्यत्रचालयेत्॥ नक्षरायेत्कुंप्रदेशे नचन्तमितंनयेत्॥ २२ विदार्येतत्प्रपतति॥ स्फोटतिक्वाथ...जनंतदनि
ष्फल:॥ क्वाथोला दोषशामनायच॥ २३ नतापनिस्यविश्रम्य॥ प्रशानंवदानदृष्णः॥ क्वाथंतंदमरजत॥ ...जनप

रिक्तितं॥ रस पिबेत्पूर्वीन तोरोगी॥ विश्वायस्वस्तिवाचनं॥ बलदक्षाश्विरुद्रेंद्रः स्तत्चंडार्कानला। निला॥ रसस्सषयः
सोषधियमं॥ स्वतसंघ्रास्तु पांडुरा। रसायन निवर्षाणां॥ स्वानाममृतं तथा॥ रद्रस्तु भास्वा त्तमनागानां॥ त्तेषज्यमिद
मस्तुता धन्वंतरि दिवोदास॥ करोजमथाश्विनौ॥ ॥ स्रस्फतं चामृतं चिवास्मरेद्भेषजकर्म्माणि॥ पात्रयात्रमथः रुचा
पश्चाउन्नानतानायत्॥ रु न पिबन्तद्रसांवारितां सलादि भूरत्नयेत्॥ अमृथ्वेशेषेस्तुकं॥ पीतंतत्वौषधं त्रासेषेन
रसा॥ नकरोतिमारे रागं प्रकोपयत्यन्यरोगांस्त्र॥ स्त कं नवीन द्रव्यं च॥ योजयं सकलकर्म्मसु॥ उत्तराणास्व
गुणैर्युक्ता॥ व्यासला भस्तवो रसा॥ वरमुक्क॥ मिपियुक्तं यत्॥ योजयेत्सर्वकर्म्मसि॥ व्याधेरस्य
क्तंमद्रव्यं॥ गणेकमपितत्पजेत्॥ रसतथा॥ त्वाक्तां॥ ॥ अतिपातिभुरो रोगे भनेत्रे पि
पिमत्तंत्तिमक॥ प्रदीमागारवह्नीश्च॥ तत्क्रयीत् प्रतिक्रियां॥ रसलंघने पित्तातस्सम्यक् हृप्सेन्न
पितलक्षणे॥ क्वरोयदिनिया तिस्य॥ तं पयाल्तिसपाच रत्न॥ रक्षत्रा र पयां करवायांस्व॥ सर्पिःक्षीरं वि
रेचनं॥ षडदंषडदंद्युज्या॥ कालं वीक्ष्यामयस्य च॥ रसलंघनं स्वेदनं कालो॥ यवाग्वस्तिक्तको रसः॥ मलानां पा
चना निरुस्तु॥ यथावस्थंक्रमेण वा॥ रसस्तु ज्ञात्मसत्वरां॥ क्षणकान्तं कुलच्छां तु पाचनमसस्य दे स्तन्॥ हिता मिद्राज
विहितांचापयां॥ रस देयं यवागूरविपाचने तैस्वे॥ रसा॥ ॥ अथमंडः॥ ॥ मंडश्चतुर्दशगुणे तोये सिद्धा
प्यसिद्धकः॥ पंचकोलकराम्लात्यं॥ भान्याकनवसाधितं॥ रसा॥ मंड स्त्रिदोषशमनः परमं ज्वरपाचनं॥ वा

५

यमंडः कषायोष्णो ॥ विबंधघ्नो माहत्शूलजित् ॥ ग्णपाचनो दीपनो ग्राही । पित्तश्लेष्मानिलापहः ॥ वाते वा सकफे पित्ते सा
मवातरुरोगहा ॥ ४४ ॥ वाट्यमंडः प्रशंसंति यदोल मगाधान्विता ॥ रक्तसाल्युज्ववोमंडा ॥ यादामधुरशीतलः ॥ ४५ ॥ श्रमदमत्रम
रोदंति वातलः पित्तवारणः ॥ ७ ॥ ॥ अथ पेया ॥ ॥ पेया सिक्थसमन्विता ॥ चतुर्दशगुणे तु सिः । पेया लघ्वी हिता ला नि
पिपासाक्रमप्रणुत् ॥ ४७ ॥ स्वेदाग्निसार दौर्बल्य । कुक्षिरोग ज्वरापहा ॥ दीपनी पाचनी दोष । मलस्येदानुलोमनी ॥ ४८ ॥
लाघवात्तंडुलीयाद्या । लाजापेया विशिष्यते ॥ ७ ॥ ॥ अथ विलेपी ॥ ॥ विलेपी घन सिक्था स्याद । सिक्था तोये चतु
र्गुणे ॥ विलेपी दीपनी हृद्या । ग्राहिणी तुत्रणापहा ॥ ॥ ४९ ॥ लघ्वी स्वादुरसा नित्यं न्नेदहा पेय गिनी । बल्या
संतर्पणी पथ्या । व्रणक्षिप्तदृष्टि रोगिणां ॥ ५० ॥ ॥ अथ यवागूः ॥ ॥ षड्गुणेऽम्भसि सिद्धा । यवागूर्विरल
द्रवा ॥ नागे कंठ तत्रकं । हिना गनजलं रक्ता ॥ त्राय पंचकोलं वधान्य च । पिप्पली वैतैस्तु तंडुलान्न संस्ति
द्धा शिथिला किंचि । स्याद्यवागूर्निगद्यते ॥ ५१ यवागूः ॥ तरट ह्मा । तिसारघ्नी बस्तिशोधनी ॥ मदात्यय मधुनित्य । ग्रीष्मे
पित्तकफाधिके ॥ ५२ ॥ गरक्तपित्तेन च । यवागूरहिता हा रा तत्र तर्पणमेव च ॥ श्रादयं तलाजसक्तुनि ॥ ५३ ॥ अ
थ तर्पण ॥ ॥ अष्टादशगुणे तोये । शृतोसृत्यं शमविडो दोषहृद्या दिव्यलता ॥ हिक्काकाधशापिते ॥ ५४ ॥ तृष्णादेशे
ष्वे तर्पणं । सर्वज्वरहरसमता दकलावणिकः सर्वा । सामिलोलदाके ... श्लेष्मलतर्पणं । दकमित्पल्लिभांच
त ॥ पथ्यः स्तनरसः सूर्यभात्रः स्वन्नतरनाशनः ॥ ५५ ॥ सरलाणमृदुतमोमोज्वो । गुरुःसौहृद्यो । विदीपनः ॥ शीतलो मधुर

11

पथ्ये । बलारोपितलो दिते ॥५६॥ रुद्दाहद्वार संश्रय ब्रणजन्तुर्दशरोगिणा ॥ लंघितायदितापेया । यथास्वयावने:स्र

ता ॥५७॥ पंचकोलकसंसिद्धा यवागूरग्निबलं घिता । अतिलंघितं तं दृष्ट्वा । तस्यसंतर्पणं हितं ॥५८॥ अजांगलंभृशु

डोपेतं पानाय ज्वरशांतये ॥ पथ्यादयं दिकोष्ठा । नदातव्यं तु रवाभिना ॥५९॥ अरुच्चायकृतं पथ्यात त्यच्यक्

रक्तज्वेत । सज्वारं ज्वरमुक्तं वा । मानवंतिक्तयज्वं ॥६०॥ दशकाला चितं पथ्यं । दिनांत भोजनं लघु । विनापित्त

षजेत्याधि: । पथ्यादवनिवर्त्तेत ॥६१॥ मन्दपथ्यावि … हीनस्य जेषजानां शतैरपि । अन्नकाल हितं चास्मै । प्र

दयंदंतधावनं ॥६२॥ व्यायस्य वक्त्ररसस्तक्षिप … रीतं प्रयोजयेत् । ज्वरिता दितमश्नीयात् । यद्यप्यस्या

रुचिर्भवेत् ॥६३॥ अन्नकाले ह्यभुंजानः … क्षीयते म्रियते पि वा ॥ उदीर्णदोषस्वल्पाग्नि र

मन्त्रुरु विशोषत: ॥६४॥ अभुज्यात सहसा षा … लो: । स्थिरं क्लिश्यति चानर: । रक्तशाल्यं घित स्यादो

विधीयक वल यद्दां ॥६५॥ लाजसक्तुकपथ्यंस्या … ता । सैंधवेन समायुतं । तद्वज्जीर्यत्य विघ्नेन । ज्वरीजीवत दा

ध्रुवं ॥६६॥ जीर्णानां रक्तशालीनां ज्वरघ्नकाथसाधित । प्रसुतलत्वादनो हितस्वि । कार्यं मूषादिको पिवा ॥६७॥ चहे

जीर्यत्य विघ्नेन ज्वरीजीवत्तदा ध्रुवं । सिद्धंदशगुणे तोये । तंडुलेन्य: परिस्कृतां ॥६८॥ तत्तमनं कृत्वमध्ये । निस्यादी वि

विरोदन: । लाजोदनो लघु: शीतां कफघ्नोदीपन: परा ॥ हृद्यनिद्रारुचिकरो बद्धो । मधुर: पित्तनाशन: । स्रुतस्वे कहि

विनारा लघु विद्यायघोत्तरां ॥७०॥ तर्पणो मूत्रलो रुच्यो । मेदोहाकर्मी तिलनाशान ॥ विवि बिजे निस्तुवेरिषङ्गुष्टे: ॥

६

सुपक्वसर्षपंचक ॥७९ स्त्रुयस्त्रृक्तं त्रिदोषघ्नं ॥ व्यंजनं तं च वैकसर्पिषा ॥ क्षउद्द्वीकरं श्रेष्ठं ॥ हृद्यं चं बलवर्द्धनं ॥८० अथ स्तुतड
वायाह्दी ॥ मधुरः स्नर्पी एगुरुः ॥ क्षयरोगहरो ब्राष्यो ॥ वातश्लेष्मविवर्द्धनः ॥८१ सर्षपवानात्तष्टानां ॥ निस्तुषाणां च सक्ते
वः ॥ सक्तवाल्दनोस्तृष्णा ॥ वातलाखल्पतर्पणः ॥८२ मेहमदकफः कासः छर्दितृट्सारपित्तनुत् ॥ अंगारमंडकाह
द्या दीपनारुचिकारकः ॥८३ तंदुलेष्टशाल्यादिजाल्लाजा ॥ अनात्तष्टयवाज्जवा ॥ लाजाः कषायमधुरा ॥ दीपना लघवाश्रि
ताः ॥८४ त्रिदोषघ्नो लघुग्राही ॥ हरीरां शस्यतिपरं ॥८५ ॥ अथ शाकानि ॥ ॥ पटोली वास्तुकामघी ॥ बिंबी च शात
भ्रष्चिका ॥ तंडुलीयकं कर्कटकं च ॥ शाकार्थं बालमूलकं ॥८६ कर्कोटं कारवेल्लं च ॥ वार्ताकं बिंबपल्लवा ॥
कुसुमानि कठिल्लं च ॥ शाकार्थं हारिणां हितं ॥८७ मांसानि लावकपिंजलेरणेः शशतेः शरालः
त्राद्रोः वालस्तुब्जैः क्रौंचगेहमगन्मात्रत्तिरवच ॥ ८८ अत्र त्वांतलघुमिर्मीसे जंगलेः हितारसः ॥ पि
शितनस्तु पीष्टेन ॥ हते मांसरसोरसः ॥८९ रसोमांस रासाहष्यः प्रीणनः प्राणवर्द्धनः ॥ वातपित्तश्रमस्वास
कासक्षयनिबर्हणः ॥९० प्रसन्नो व्रणशुष्कानां ॥ क्षीणानाश्रुह्वकाक्षिणः ॥ स्मृत्योजः स्वरहीनानां ॥ हारदीपग्रह
तारसां ॥ भग्नसंश्लिष्टसंधिनां ॥ हृद्यात्स्नुः श्रवणाधिनां ॥ आप्यायनहादननः शुक्रोजोबलवर्द्धनः ॥९१ कट्कुटांश्चमद्य
रांश्चातितिरिकैांश्चवर्जिकान् ॥ गुरुस्तनानसंसति ॥ क्षारकत्रिबिकिस्मिका ॥९२ लंघनानानिलबलो ॥ हारयद्य
विकं लवेत् ॥ निषमं मात्रा विकल्पज्ञो ॥ दद्यात्ता नयिकालवित् ॥९३ ॥ अन्नमत्तनक्र सिद्धानि स्वच्छानि व्यंजनानि च ॥

कषायपानपथ्याद्यैः ईश्वादमतिलंघिते ॥७८॥ सर्पिर्द्वियं कफे मंदे वातपित्तोत्तरे हितं । अजारस्थविरुद्धाहो । वेगोस
गैर्यिघोदितं ॥७९॥ लघुताकुत्यिया ग्राचाजीर्णाहारस्य लक्षणं । अस्लंबुवानुपानार्थी ईषिनायप्रदापयेत् ॥८०॥
मद्यंवामद्यसात्मायासा नाहाययथाबलं । मद्यद्रुराणां मंदानां अर्यवान्नोपिदितं हितं ॥८१॥ वाताम्लासैंधवोपेतं । पित्त
स्वाडुसशर्करं । व्योष क्षारयुततक्रं कफार्तेषु कपीडितं ॥८२॥ सातत्यिपासाद्यनावाध्व । पथ्यं छपचमागतां कल्पना
विधिनास्तोस्तेः । प्रियवंगमानस्तुनः ॥८३॥ दोषक्षसंभ्रम । यद्दीणे । बलक्षीणोपिवानरः स्वयो निवर्दनंनोक्तु ।
मन्नपानंप्रक्रांक्षितिं ॥८४॥ यतयदाहारजंतं हि हिसाः प्रार्थ्यतनरः तस्मैतत्र दातव्यंतं तद्दूयमपोदि
ति ॥८५॥ अक्लिरवोजानानांशो । पानानेकंप्रन रायत ॥ आश्रयंपवनादीनां । चतुर्थमवशोष
यत ॥८६॥ उष्ट्रहष्टि विनाशोस्तु । पुष्टिरस्तुकलवरे त्नुकंत जीर्यतामंत्र । चिरंजीव निरामयः ॥८७॥
लवणदत्सुमानत । दूत्यतांरवरात्रवः । हष्टिदोषवि. नाशार्थसंस्मारनादद्मुनि ॥८८॥ अगस्त्यंजलक
संचोसठुड्रवडवानलं । आहारपरिणामार्थं स्मारञ्जीमं च पंचमं ॥८९॥ इति कायस्थ चामुंड कृतज्वरतिमिर
नास्करेअषष्ठदिपरिक्रमनामाष्टतीयाध्यायः ॥ छ ॥ ॥ श्री ॥ ॥ अथ साधारणाव सर्वज्वरचिकित्सितं ॥ ॥
॥ नदिव्हाराउबध्नाति मारुताद्यैर्विनाहतः । चिकित्सब्रुवारान्नसर्वानू । निमित्तानां विपर्ययेः ॥१॥ ज्वराद्युक्रम
कारउाद्यात सामपक्वारानरत । पाचनैः शमनैः क्वाथैः । दोषत्राषउ निर्दरत ॥२॥ पाकशीतकषायवं

७

मुस्तापर्पटकं पिबेत्॥ सनागरं पर्पटकं। पिबेद्वा द्वराऽउरात्तनं॥३॥ किरात तिक्तकं मुस्तं वा गुडूची विश्वभेषजं। सपुष्पिदं
किरातं वा। यागेन्द्रीरं च वालकं॥४॥ पिबतश्च त्र निंबा गुडूची मुस्त नागरं। नागरं देवकाष्ठं चा हन्ती तो क्षत्य मवचा॥ पयथायोग्य
मि मयोग्या॥ विसृज्य भिषजां वरेः॥ ज्वरघ्नादीपनाश्चैता कषाया दीपपाचनं॥ हृष्टस्मा स चिप्रशमना॥ खरव विरस्यनाशनः॥
शुंठीक्षन्यगुडूचीनां। क्वाथः सर्वज्वरापहः॥७॥ गुडूची निंबधन्याक। चंदनं पद्मकान्वितं। हृष्माद दद्दसचिह्नदी सर्वज्वरहरे
गणः॥८॥ तिक्ताऽनंतांबु विश्वाह्वे॥ क्वाथो वान्नर्पष्टिसाके॥ ज्वरहृत्त्रमसं माद् ध्रमकामक नाशनं॥९॥ आमलक्य
नयाहृस्ना॥ क्वाथाहृदसचित्रकः। सर्वज्वरकपातंक॥ न दीदीपनपाचनः॥१०॥ मजीरं सैंधवा पृतं। वासीवाऽभ्रवा
रिचिः। चक्षुष्यदीपनं हृद्यं। कफारोचकनाशनं॥ ११॥ मूलपंचं घोषधच्छिन्ना। किरातः पंच तिक्तकं॥ क्वा
थादंतिश्वासकासो॥ ध्वंसामष्ट विधज्वरं॥ १२ किरातं वा विषाम्छंगी॥ क्वाथो दलहृष्टा विरोचकः। सम्यग्दंसन्निपा
तं च। नाशायनात्र संसयः॥ १२ छिन्नोषधः। एकं तिक्त। धन्व यासंरजाष्टकं। एकमसाम्रता नाम। क्वाथो देषट्ट आपहः॥
४॥ सर्वज्वरहरं हृद्यो कषाया यामम्रतोपमं। त्रिकर्षं पंच कर्षं वा। सप्तकर्षमथापि वा॥ १५ प्रशासंशमना। देयं स्पान्नवक
र्षिकं। रा निंबपत्रं सोशीरं। विज्ञेयं सप्तकार्षिकं। एकर्षं त्रपटालं च। मधुकं त्न हरोहिणी॥ १६ एतदेव सक्षुरवं। स्यात्साल
यं पंचकार्षिकं। सनिंबपत्रं सोशीरं। विज्ञेयं सप्तकार्षिकं॥ १७ चक्रवन्न सप्तकर्षस्या पटोलेनारग्वधस्य च। संनिपातप्रशमनं।
विज्ञेयं नवकार्षिकं॥ १८ एतादवकषायं त्र। सर्पिषा सह संयुतं। वातपित्तसमुद्भूतस्या ज्वराणाममृतोपमं॥ १९ मुख

स्नेलवणं दद्याद्धातकीश्लेष्मोद्भवे ज्वरे। शर्करासंयुतं पीतं। पित्तज्वरविनाशनं॥२० सौद्रेणसह संयुक्तं। कफज्वरहरं परं। गो

मूत्रेण॥ मायुक्तं। सन्निपातज्वरापहं॥२१ कं विकिमित्यषं। ब्रह्मणा भाषितः स्वयं। ऐंद्री तिक्ता हटत्यघ्नी। कुबेरे

लेयकोद्भवैः॥२२ आमज्वारन्नदाखव। हरीसैंधास्तोदूरा विजित। कटूफलं पोष्करहस्ना॥ शृंगी चमधुना सह॥२३ का

सश्वासज्वरहरः। श्लेष्मोत्लेदः कफांतहत। हस्तामधुकिरातानां। कणमक्षकसारयोः॥२४ कणगोमूत्रहस्तानां। लेदे

नस्पांजनं हस्माद्। कुलत्थमाषनिष्पावमुंजाढक। विचित॥ नपयूषः सर्वज्वरहरो। दीपना पाचनो लघुः। श्लेष्मा

रुविरुद्धनादंगमर्द ॥ दिवा॥२६॥ पंचामृतरस॥ ॥ ॥यच्चमानं निरामत्वा। निष्ज्यंदायये चवित्। कचिदा

मज्वरेप्रोक्तं। सरसिंघसंमतं॥२७ रविरसमस्त मुद्दफेन हिंगुलगंधं परिमिर्द्दयामं। नवज्वरे वल्ल

श्रुगं विघस्त्रं। आर्द्रांत्तसायां ज्वरहमके॥२८ गंधक टंकण गंधसम। वेल्लजानां क्रमांशकः। तत्तुल्यं सि

तयायुक्तं। सर्वसंज्वर्षीयन्नतः॥२९ ताम्रारव्यमत्रपाचितं ना। सावायच्च त्रिवारकं। पीष्वसुंदरीनाम। गुटिकावल्लस

म्मिता॥३० देयाद्रकरसेनाथ। नवज्वरविनाशनी। पथ्यं दद्यात्तक्रंयुक्तं। दिनांतज्वरितलिषक॥३१ शीतोपचारि

वातादि। विदध्या दोषधाकले। रसगंधं विषंताम्रं। नेपालं गुग्गुलं तथा॥३२ गुटीवल्लमिता खौद्र। द्रुता सर्वज्वरापहा॥

॥ इति कायस्थवामुंडकृतज्वरतिमिरभास्करे रसाक्षरणज्वरचिकित्सा नाम चतुर्थोध्याय:॥छ॥ ॥श्री॥ ॥अथ वाता

दिज्वरत्रितयस्पलक्षणं चिकित्सा च॥छ॥ ॥तत्र वातज्वर:॥ ॥कटुतिक्तकषायैश्च। रूक्षाल्पाया मजागरैः। वेगसंध

8

रणैः शोकचिंताद्यैः कुप्यतेनिलः ॥ २ जंघाकंयोर्मध्ये यो विशोषो विनिद्रता । स्वशिरोरुक् कर्णरुक् शंखसं
बस्तिरुक् ॥ स्वक्षणे च रुजाध्मानं । पिंडको वेष्टनं श्रमः । स्तब्धता पाद यष्ठ्रक् । कासश्चैव दिनांतिके । २ रूक्षध्म्रा
रुणं च यविट्ठ न ष मूत्र मरवा छिता । जिह्वाध्म्रा खरा तिक्ता । करवायं विरसं मुखं ॥ ४ मंडः शीतो स्मतास्ट्रे । शष्टेवा
नालवायिवा । सर्पवदु कगा नाडी । ज्ञेयं वातज्वरे गिरं गितं ॥ ५ पानीयं यादृशीनोस्नं पेयं स्याद्धुषितं त्प्लेततदेव विषवत्
शेयं । शीतमुष्णी हतंडन ॥ ६ स्त्र्यी मितमलोष्टासा । स्वर्स रूप्पायसादिके । उष्णीकृतं जलं पथ्यं दोषट्ठ्र कासजि
त्सह्य ॥ ७ नलंघये न लंघ्य त्रेन संरुकंल ह न षडंदमंत नलंघयत्रिरामंत्र छद्वात हिरो गिणं ॥ ८ युक्तं लंघि
त लिंगेस्तु तं पया त्रिस पाचारत्मद्धिष्व सिशिरः श्लेक्षुद्रागोक्षुरसाधितं ॥ ९ पेयावातरुजात्रसिप
स्सास्सादयान्निमरुरिः ॥ पिप्पलः पिप्पलीमूलं द्राक्षा मलकनागरैः । काष्ठविबद्धे सरुजं । पय उपति
कीर्तितं ॥ १२ मस्तर हजगोक्षुमा जलकेनव एपन्द्रुतः यूषावातज्वरं हंति मुज्जामलकया पिवा ॥ १३ स्त्रा
वल्लोयाय वान्यस्य । हदष्टीपंचमूलकं । छिन्नायं योष्धं वापि पाचनं येति कज्वर ॥ १४ ॥ अथ रामनः ॥ ॥
छिन्नोषधाः सदस्यरैः क्वाथो वातज्वरं जयेत् । किराताद्यामृतादीव्या हहती द्वयगोक्षुरैः ॥ १५ सस्थिराक
लश्री विस्वैः क्वाथो वातज्वरायदः ॥ १६ पंचमूलीबलारास्ना कुलस्थिस पोकरैः पर्वीलद्रशिरः कंपदु
तेह न्म कुक्षरा ॥ १६ गडूचीसारिवाद्राक्षा शतपुष्पी पुनर्नवी । कषायसगुडः पोता सद्यो वात विनाशकृत् ॥ १७

शतावरी छिन्नरुहा। स्वरसं गुडसंयुतं। वातज्वरहरे चूर्णं। केवलो वामृतारसः॥१७ केवलीय पंचमूलो छो। यद्वा
यासात्। ताज्वरः॥१८॥ स्वेदनं॥ ॥कर्पासास्थिय वेरंड। वर्षाभू तिलसर्षपैः। छन्नोतिसी कांजिके स्वेदो वा
नीविनीसनाः॥२०॥ श्रोतसां मार्दवं कृत्वा। निन्वापावकमायां। दत्वा वातकफस्तंभं। स्वेदो ज्वरमपोहति॥२१॥ बोध
नं॥ ॥विट्सैंधवशृंगीनां। चूर्णमम्लैः पिबन्नरः॥ ...ताहिति विरकाय। लांगलानां रसेन वा॥२२॥ शाकरीदाडिमा
न्यां च द्राक्षा दाडिमयोस्तथा॥ विरस्ये क्षारय कल्कं। गंडूषं वयथाहितं॥२३ क्रियायास्तु गुणालाभे। क्रियाम
न्यां प्रयोजयेत्। पूर्वस्यां शांतवेगायां। न क्रिया संकरो यतः॥२४ षड्भिः केचिदहोरात्रैः। केचिद् द्वाभ्यां तिर
वचा इच्छंति मुन्यः प्रायो। रसानां परिवर्तनां॥२५ परि हृत्यो रसस्यैव। शांतवेगः क्रिया तावत्। गु
लान्न विकल्पा। विश्रामांतरिताः क्रियाः॥२६ सेवा न्यथा नाव तस्मात् सर्वं वितसकरा ज्वरं॥२७ अथर
सोः॥ ॥पारदं समकं तालं। ताम्रकं टंकणं मकासवाम तस्सम अभ्रकं कारवल्याद्वै दिनं॥१ मर्दयित्वा न
दिसाव। ताम्रपात्रोदरं घनं। अंगुली धार्दमानेनायाव सिकता। सिकताकाये। यंत्रयावक्तुतटं तपेत्। त्रीदयस्तस्य
पुष्टः॥ ततः शीतलं याल्लं। ताम्रपात्रोदराद्बुधः॥ रातं सं भमरि वंदद्यात्र दीमकत्र चूर्णयेत्। शीतन्नंजी रसो
नाम। हिंगुजं वा तिकत्वा। रात्रर दातव्यं पुसे षाडनात। चूर्णं नागरायज्वरी। हिंगुलं च विकंचास्मा। हिंगुजं मस्तुता
सह॥ रत्नसद्यो वातज्वरं दंति रसोयं हिंगुलेश्वरः॥ छ॥ ॥इतिवातज्वरचिकित्सा॥ ॥वितादलिनवसैप्सीदोः

९

कोष्ठे तैलखरातैपेः॥ अपक्वासाम्लदध्याद्यैः॥ पित्तं कुप्यति देहिनां॥ ५५ तत्र सप्तेदोरतिमूर्छा। कोपो गेछकछ्रीवनंमदः॥
सारस्वद्न्हर्दिविगंधा। शीतच्छायमुजर्ज्जः॥ ५६ पलायाश्राणक। गछ्छसुखपा। कोप्दिसाम्ब्रच। पीतं वा हरितं त्वगू
विड्नखमूत्रमुखादितं॥ ५७ जिह्वापीता तिरक्ता वा। मुखं तिक्तं ज्वरो षमुख्रू॥ स्फवोदाहनावकुष्टं त्राक्षेसा
मूरवछृता॥ ५८ नाडी पित्तवहा रक्ताकाकेकलाचकगामिनी। जलमूर्धीव विशिष्ट। षडंगादिगसेः स्मृतं॥ ५९ [illegible]री
तंस्तोकं प्रदातव्यं। पित्तश्लेष्मज्वरघ्नघा। तृष्णापित्तादितेन। स्तिा [illegible] तानास्मूभणा विना॥ ६० तस्या[illegible]पित्ते विकृत
नि। तपजेत्पित्ताधिके धिकं। पित्तज्वारण तीव्रेण दह्य मानस्य देहिनः॥ ६१ प्रवात मंदिरस्थस्य। कुर्यात्सी
तादिकाः क्रियां। बलावराधित्रिकार्यं लंघनं वदि नत्रयं॥ ६२ केपि पित्ते न त्रांसंती पेयाबेस्तु गुण
चारत्त। पित्तघ्नौषधसंसिद्धा। पेया पित्तज्वरे हिता॥ ६३ अम्ला त्तिलारविता मेव। दाडिमाम्लासा सैंधवं। त्स्ट
विट्पैत्तिके वाध्य। शीतां च मधुसंयुतां॥ ६४ पिबेत् दाहत्र मन्नितं। कामं निरन्तं टलया। ददितां शार्करा मधुसंयुक्तं
पाययल्लाजतर्पणं॥ ६५ पक्षुणस्वोदानादेयः। वितथ्यापैत्तिके ज्वरे। खजा नाम जली सहीयष्टीमधुकसा। धृतं॥ ६६
पाक्वं सितकणायं वा। पिबत्पित्तज्वरापहं। कलिंगकटुफलं मुस्तं। पाठा कटुकरोहिणी॥ ६७ पक्वं तु शर्करया पीतं
पाचनं पित्तकेज्वरे। अथवा पाचनं ग्राह्यं। पटोलं सकिरातकं॥ ६८ धन्वयासा[illegible] निंबं। [illegible] पर्पटकं तथा। किरात
तिक्तं कुबेरं। मामलक्यफलं लघु॥ ६९ ज्वरघ्नं त्रिजिं शीतं। पाचनं पैत्तिके ज्वरे॥ पण॥ ॥ अथ शमनं॥ ॥ विश्वाम्बु

४०

पर्य्यटाब्राह्मी । घनचंदनसाधितं तत्क्वाथं सुशीतलं वा । हंति तृट्छर्दिज्वरदाहमुत्तर ॥५१ पादशेषे कषायं स्यात् षोड
शगुणाम्भसा । कथितात शुंठ्या: द्राक्षा लाक्षा नवज्वर ॥५२ कटुरोग ॥ ॥ किराततिक्तामृताब्राह्मीरजः शीतांश्च प
पाके ॥ क्वाथो वम्योमरुत्स्वासः । पित्तश्लेष्मदाहमापह ॥५३ गडूचिमुस्तधन्याकं मधुकं कटुरोहिणी । इन्द्रासु
लासचिछर्दि पित्तज्वरहरा मताः ॥५४ मधुकं त्रायमाणं च । पिप्पलीमूलमवचा । किराततिक्तकं तिक्ता । मुस्तकं च
वितीतकं ॥५५ सशर्करीर्योतामतं पित्तज्वरनिवर्हणं ॥ गुडूच्यामलकेश्चुका । कवलो वापि पर्पटः ॥५६ पित्त
[illegible] बम्भान्वितां पटोलयव । निक्काथो मधुनामधुरीकृतः ॥५७ तीव्रस्यपित्तज्वरा
मर्दी ॥ पानात् दाहतृष्णाशान ॥ श्रीपर्णीचंदनाब्दी रं ॥ परूषकमधूकजः ॥५८ शर्करा मधुरोद्धं ति
कषायः पैत्तिकं हरं । उदंबरं शीघ्रा छिन्ना । ससिता पैत्तिकज्वरा ॥५९ पटोलेंद्रयवाक्वाथः समधुः पि
बदाहजित् ॥६० ॥ शोधनं ॥ ॥ मस्खंडं वा हरीतक्या पीत्वाति क्ते विरेचनं । द्राक्षा खर्जूरवर्धनमीक्षाथ त्रिकान्वेया
न्वितः ॥६१ शोषो भ्रम मूर्छा । पित्तज्वरप्रलापन्तुत्तर ॥६२ ॥ रक्तपित्तज्वरः ॥ ॥ न्यूनिंबातिविषा लोध्र मुस्त
केंदुयवामृता । वासकं नागरं बिल्वं । कषायामाक्षिकान्वितः ॥६३ श्वासं कासं च विच्छेदं रक्तपित्तं ज्वरं जयेत् ॥ द्री
वेरं चंदनं धान्यं । पद्मकं यष्टिकामृता । एषो ब्रह्मरुजतः क्वाथः । शर्करामधुसंयुतः ॥ रक्तपित्तं जयत्युग्रं । तृष्णादा
हज्वरापहं ॥६४ आटरूषकमृद्वीका । पथ्याक्वाथः शर्करा । मधुमिश्रः स्वासकास रक्तपित्तज्वरान्तकृत् ॥६५

१०

ष्टषडुष्णहदरसः शर्करामधुसंयुतः॥ रक्तपित्तहरं हंति श्वासकासं च कामलं॥ ६६ पीत्वा सशर्करं क्षौद्रं। चंदनं तंडुलांबु
ना। दाहतृष्णाप्रमहस्यो॥ रक्तस्रावप्रमुच्यते॥ ६७ स्वरसं माडुलिंगस्य सक्षौद्रं मधुसर्पिषा। तालुशोषप्रदेहोयं मूर्द्धि द
यः ससैंधवः॥ ६८ पथ्या तिलघृतक्षौद्रं। लेपादाहहरायहा कासाः स्रक्पित्तवीसर्पश्वासानहंतिवरामपि॥ ६९ हरीतकी
प्रियंगुश्च। पिप्पली रास्नामवचा दार्वी हरिद्रा तजोद्भवा। सद्दोद्भुखवधावनं॥ ७० पतनकुत्तावेश्च मुखरोगप्रशमनम् तिव
क्रं विशादशामति नक्कांदाचजायता॥ ७१॥ रसः॥ छ॥ ॥ शीतं तंजीरसोपेव गुंजिका सितमासरुः। पित्तज्वरहरेन्नूसं
वर्म्मस्तानपानतः॥ ७२॥ इति पित्तज्वर चिकित्सा॥ छ॥ ॥ मधुरातिगुरुस्निग्धदधीप्रधनवाचाकेः श्रमायामदिवा
स्वप्नैः कफस्याद्विषमाशने॥ ७३ रकास्थासशति रुपाय। प्रसेकश्चर्द्दौरा नकाः। निद्रागुरुत्वरुल्लासास्ते
मितोष्मा तिलाबित्ताः॥ ७४ श्वेततां नजतेत्वरुविन्न स्मस्तखता द्विशा। जिह्वाश्वेता घनाचाढी मुखस्तंष्कफ
बिलं॥ ७५ सस्वैर्गीत … ज्ञेया। शाष्टेगशीरतामताना …श्लेष्महरद्रहंस। पाराश्पतकपोतये॥ ७६ ऊर्ध्वदिश्यगति
है। लिंगं श्लेष्महृद रविङ्ः। पानीयं पादशोषं स्यात्। उष्णसोव … दितं॥ ७७ कफजे कफवातान्छ मादाग्निबलत्तच्छल
घानैः सप्तत्तिः शुद्धिः कार्या शीतं वसंतयो॥ ७८ श्रीपर्णी बिल्वटिंडुकतर्कारी दक्षीरी पाटलाश्चिन्निः॥ सयाविकाथितं
पेया। श्लेष्मज्वरदराहृतं॥ ७९ मुद्गयूषोदनश्चापि रूक्षः कौलत्थजांगला पिवा। दिवानिद्रां नजबीत विधिः स्यात् श्लेष्मिके ज्व
रे॥ ८०॥ पाचनं॥ ॥ लुंगनागरैःषधंदीप्य। सिंधुक्षारकणायुतं। पाचनं कफजे घृष्टाद्यायवानप्यावबोधये॥ ८१ अथवाह

४४

रुगांगेयै। शृंगबेरडुरालभा। रुस्माकौ शिकरहृत्नी तकडुकाकीटहिषवि त्र्यकं। डेक्वार्यंपिक विश्वभेषजवरा मूर्वा विषा
जीरके। पलाशमदरेणुकोषणत्वग्री चव्ये तत्सम्यग्गुते:। तारीदीपकसर्पी पिथ्वक फा। जक्रयोंद्दा रपाचनं। ६२ त्राकं
॥ ॥कट्फलोया। त्रयाह्वा ६४ शृंगी न्त्र निंबपर्पटं। तारीदासच सचोढ्। क्वाथाद्दंतिकफहरां। ६५ सिंधुवारदलका
थाकणाढ्यं कफज्ञेह्वा। जेघयोश्ववले दीए। कर्पेत्ययिदि [illegible] तुया ६६ कंटकारीकणाशृंगी। गुडूचीक्वाथपानतः का
संस्वासंहास्स्थात्। मंदाग्नि [illegible] संजरोत्। ६८ दर्वांग [illegible] वाथस्रुंठी गेहि षजोथवा। मुस्तात्पटरूषको वा पिसद्दा
सारुइजे तिं वा [illegible] यापदिकाक्वाथे। [illegible] वारदराभता:। वास्तापटोलत्रिफला। छिन्नतिक्ताज्जतोः
घवा। ७० तिक्ता विश्वनिशा वोष। शताह्वा त्रिस्र [illegible] तंजायता ला। पिबेत्कफज्वरं घोरां दंतिकासंसमन्वि
तं। ७१ कट्फलं ब्रह्मा शृंगी। कटुकं मुस्तकं सठी स [illegible] मस्तान्येकशो वा। पिश्च द्वारात्रसी निकारयेत्। ७२ तक्या
ट्किासदोढं। लिह्या कफविनाशनं। श्वलानिलारुचि [illegible] वह्निकासश्वासहृद्यापहं। ७३ अजाजी शर्करायुक्ता। दा
डिमस्वरसनवा। रुचिदो सम्बन्धालक्त:। कत्रिककवलग्रह। ७४ रोधनं॥ ॥सद्यो ज्वरस्य संजाता हस्ते सामे विशेष
त:। कषायनंवमनार्हस्था। अन्यथा व्याधिद्वेत्। ७६ चसमदनपिप्पली। कल्कक्षौद्र समन्वितं। पायायान्मधुकक्वाथ
मेतद्वमनमुत्तमं। ७७॥ रस:॥ ॥शीतलं जीरसोप्युत्रं। देयोगुंजात्रयेमितः। सद्योज्वरहरं हंति। वासस्यापानपाने
न। ७९॥ अथ सन्निपातज्वर: ॥छ॥ ॥इतिकाल [illegible] तहरतिमि [illegible] वातपित्तश्लेष्मज्वरचिकित्सा नाम॥

पंचमोऽध्यायः॥ छ॥ ॥५॥ ॥ अथ द्वंद्वजज्वरत्रितयचिकित्सा॥ ॥ निदानं मिश्रितं ज्ञेयं द्वंद्वजे ज्वरत्रये। छर्दिर्मूर्छा शिरोर्तिस्तृ
ष्णा कासो मरुत्पित्तं॥ स्तंभः कंपो दाहमोहौ शोषः पर्वव्यथारुचिः ---- ---- ॥१॥ वातपित्तज्वरे नाडी
सर्पभेकगतिर्भुजः॥ मूत्रं तु मिश्रितं यच्च सिद्धार्थतिलसंनिभं॥ अमल सफेनिलः स्यामः॥ पित्तरक्तश्च तद्वृत्ती॥ रूक्षे रक्ते सपीते
वा मुखे कषायतिक्तता॥४॥ जिह्वा स्त्रावरवरा रक्ता॥ शाखैवैवं यद्भया। स्मृते शीतोष्मतां ज्ञेया। लंघनं नवपंचवा॥५॥ अष्टेत्त्यः
पंचविंशं तु ... वाशीतं पिबेज्जलं॥६॥ पेया॥ ॥ विश्वाबलाष्टय कृष्णी॥ नागरं धान्यकोत्पलं। एतैः पेयाष्टेरता देया। वातपित्तज्वराप
हा॥ ... दाडिमाम्लमुभाग्यं। द्राक्षाभीनिलये त्रिका। ह्रस्वमूल कजो वा पिवातपित्तज्वरापह॥७॥ पाचनं॥ ॥ किराताष्टेरभ्रमं
ता। सछिन्नविन्नता ये त्रिके। पाचनं शमनं वाथ्य ---- ---- ॥८॥ गुडूचीपर्पटं मुस्तं। किरातं विश्वभेषजं। छिन्नापर्णी
द विश्वा ... नासा ... ॥९॥ वातपित्तज्वरापह्यं पंचभद्रमिदं स्मृतं॥ ॥१०॥ पटोलमुस्तसम्पाक। निम्बयष्टे नित्राम्बुरेः
सोशीरैः मंददन्त्वाह ... पित्तानिलापह॥११॥ आरा श्रीमत्तेरंडाचंदनोशीरपर्पटैः। ... जल्या ... शुष्की वेरैः कषायं त्र
पिबेन्नरः॥१२॥ ... लदाहरः कंप। वातापित्तज्वरापह॥ ॥ पटोलं तथा चंदनं अमृता कटुरोहिणी। एषः सिद्धः कषायः स्या
त पित्तज्वरापहो॥१३॥ द्राक्षामधुकमधुक। रोध्रकाश्मर्यसारिवा। मुस्तामलकह्रीबेरपद्मकेसरपद्मकं॥१४॥ मृणाल चं
दनोशीर। नीलोत्पलपरूषकं। काषो हिमो वा ... दीर्यतीज्वरमथवा शीत॥१५॥ युक्तो मधुसितालाजैः। ...
त्तजं। ज्वरं मदात्ययं छर्दि मूर्छादाहं श्रमं भ्रमं॥१६॥ ऊर्ध्वगं रक्तपित्तं च। पिपासा कामलामपी। त्रिफला शाल्मली रास्ना राजवृ
क्षाटरूषकैः॥१७॥ ... वातपित्तोद्भवं ज्वरं॥ किराततिक्तममृता द्राक्षामलकं सुंठी। निःक्वाथ्य पिबेन्निलत क्वाथं

मधुयुक्तं पिबेत् ॥ स्वरसः ॥ ॥ त्रिफलामृतलोद्रं च तत्समांशं [illegible] सितां । सर्वमंजनपत्रस्य । त्रिजातकशिलायतः ॥ ३१ ॥ चूर्णमेतत्तुल्य
तुल्यांशं सर्वेषां च शर्करासिता । क्षौद्रेण वटिका कार्या कर्षमात्रं तु भक्षयेत् ॥ ३२ ॥ वातपित्तज्वरं हंति अम्लपानं विनाशयेत् ॥ ३३ ॥
॥ ३४ ॥ इति वातपित्तज्वरचिकित्सा ॥ ॥ स्तैमित्यं पर्वणां भेदो निद्रा स्वेदोऽथ गौरवं । शिरोग्रहः प्रतिश्यायः कासः श्वासोऽथ स्रु
लवान्याः ॥ ३५ ॥ संतापो मध्यवेगश्च । वातश्लेष्मज्वराकृतिः ॥ वातश्लेष्मज्वरे नाडी । गतिः सर्पमरालवत् ॥ ३६ ॥ [illegible] सितं स्नि
ग्धं ॥ [illegible] ॥ मलः श्यामारुणः स्निग्धः वक्त्रं [illegible] ॥ ३८ ॥ मूत्रं कषायमधुरं । जिह्वा [illegible] सिता [illegible] ॥ रा
[illegible] शीतादितानं वत् ॥ [illegible] लंघनं दि[illegible] मितं चांबु [illegible] ॥ ४० ॥ पेयादि ॥ ॥ गोक्षुरं [illegible] रु
[illegible] गुरुहा वाति[illegible] पिबेत् । तन्नापेयाः श्वासकासावा [illegible] तश्लेष्मज्वरान्वित ॥ ४१ ॥ [illegible] मूलक [illegible] । वातश्लेष्म
ज्वरे हितः ॥ ४२ ॥ पाचनं ॥ ॥ वातश्लेष्मज्वरे स्वेदं कारयेत्तु विधानवित् ॥ किराताद्यमृता विश्वैः । पाचनं
कफवातजे ॥ ४३ ॥ [illegible] वातकफज्वरार्त्तेषु [illegible] सकासास्य विविड्विबन्धे । हितं जलं दीपनपाचनं च । पटोल
शुंठीयव पिप्पलीजं ॥ ४४ ॥ आमनं ॥ ॥ कट्फलं दारु [illegible] । सा[illegible] विश्वमतीकः ॥ क्वाथो हिंगुमधु[illegible]
टः ॥ कफवातज्वरकासः । ष्ठीवनस्य [illegible] मुस्तापर्पटकं [illegible] ॥ गुडूची [illegible] ॥ कफवातरुचिछर्दिः । दाहशोष
ज्वरापहः ॥ व्याघ्रीशुंठ्यमृताक्वाथो पिप्पलीचूर्णसंयुतः ॥ [illegible] वातश्लेष्मज्वरश्वासः । कासपीनसशूलजित् । दशमूलीस

१२

पेयः कणायुक्तः कफानिले ॥ [illegible] अविपाकेऽतिनिद्रायां । पार्श्व[illegible] सकासाका । [illegible] ताम्रतामूलिः । [illegible]
रघा ॥ [illegible] तिक्ता । [illegible] गुडूची [illegible] वा । [illegible] वातज्व

रक्तलं श्वासंकासंजयंतिहि॥मातुलुंगफलकेनरोधृतं। सिंधुजन्ममरिचान्वितेन॥रएँतुखेदंतिवातकफरोगमास्यगं शोष

मास्युजडतामरोचकं। सच्चुनिंबमृतादारुकट्फलंकटुका वचा॥अथ कषायं पाय यदाष्ठ। वातश्लेष्मज्वरापहं। पर्वलिदहिरः

कंपा कासारोचकपीडिते॥ अथ रसः॥ ॥सूतकंटंकणं गंधं शुद्धंनूर्सर्पिसमं समं।सूतका द्विगुणं दद्यं। नयानेत्र भवजि

तं॥ अथ सेंधवंमरिचं चिंचा।चक्रनस्मशर्करा। पिचाप्रत्येकं सूतउच्चांस्या।जंबीरमेर्दयदिने॥अथ रससरीता रितामा

यां॥वातश्लेष्मज्वरापहः॥ द्विगुंजंतप्रतायेन॥ शीतज्वरहर: पर:॥अथ त्रिवातश्लेष्मज्वरः॥ ॥स्तंतस्पा दोषषालिंग

तिक्तास्यता: शीतदाहारुचिश्वेदमोहान्विता॥ कासतृष्णा   संतंद्रामदा: सत्रमा: श्लेष्मपित्तज्वरसामिसाध्यमा॥ र

॥नाडी   पित्तकफोत्कृते नेकहंसगतिर्चीवत्र। मंडूकं च पादतं

स्निग्धामन: पीतारुणः सितशुभ्रठनत्रास्तकवर्षाना मुखं   मर्षसतिक्तकं। जिह्वासपाटली लिप्ता शष्कांगतीसस्सु

ट॥ अथ स्पर्शेत्रिमिता। स्नान।चिवालंघनंनं वपंचकं। अतंकत्र   श्लेष्मो।गुणाशौचं उरत्ताशीतं पिबेत्ततः॥ अथ पेयादि॥ ॥

॥पाटलयवक्षन्याकमुस्तामलकचंदनेन॥ पयाश्लेष्माणि पित्ताच्छ।सारट दृच्छ र्दिदाहहतुत्र॥ पथ्यस्ताय पर्पटकेवात। निर्द्रदन

प्रसाधित:॥ कफपित्तज्वरहरा॥ अथ बाक्षन्यपटोलाया॥ परपाचनं॥ ॥तिक्तायंत्रिपाटोलाढ्ये: पत्रं नंकफपित्तजा। पटोलीक्षुन्य

जावापि। पटोलैराषधजो पिबा॥ पर शमनं॥ ॥अमृतेंद्रयवारिष्ट।पटोलं कटुरोहिणी। नागरंचंदनंमुस्तं। पिप्पलीचूर्णसंयु

तं॥ पर अमृतारिष्टमित्यतत्र। पित्तश्लेष्मज्वरापहं। हल्लासारोचकाछर्दिरेट्स्मादाहनिवारणं॥ अथ नागी स्त्रिराक्ष त्रिकाद्रै॥

विश्वगोक्षुरसुभक्षारेः॥ पित्तश्लेष्मज्वरस्य [illegible] ॥ [illegible] पीतं त [illegible] हितं खंडरी॥ ह्रीवेरं कट्फलं निशा॥ कफपि
त्तज्वरघ्नोयं॥ कासहृत्तत्स्थूल नाशनः॥ [illegible] जीवकः॥ पित्तश्लेष्मज्वरे हिंदाद्दकं [illegible]॥
पणा॥ पिचुमंदशोणचंदना पद्मका [illegible] दनं॥ [illegible] पिंडला॥ शीतं तोयं [illegible] पुल्वणदाहतृष्णावमिकरं ज्वरं जयति॥ ५५ गुडूची
हृतीत्युग्मा सदादार्वी [illegible] तेन कफज्वरा॥ ५८ वासकं पद्मकाष्ठं च॥ नागरं चंदनं मुस्त
पाटोलंक्ष [illegible] लादाद्दं दंत्यह्रियाणीजं॥ ६३ द्राक्षा संपाक धन्याकं॥ कं
टुकामुस्तयष्टिके॥ [illegible] दावर्त्तीस्थूलं पित्त [illegible] ॥ ६४ नागरं चवं मुस्तं॥ चंदनं कटुरोहिणी॥ पि
प्पलीत्वर्ग्ससंयुक्ता॥ कषायं उ पिबेन्नरः॥ ६५ [illegible] सूचिच्छर्दि॥ पित्तश्लेष्मज्वरापहं॥ पटोलं वासकं
त्रिवाम्रुस्तकं रक्तचंदनं॥ ६६ धन्यकं पर्पटं शुंठी॥ उशीरं कटुरोहिणी॥ समनागेः श्रृतं तोयं॥ सर्वज्वरहरं पिबे
त्॥ ६५ पित्तश्लेष्मदाहशूलघ्नं॥ मत्तपित्तविनाशनः॥ यवपद्मक धन्याकं॥ ६६ हरिद्रे सचंदनं॥ ६६ गुडूची देवकाष्ठं चातेजो
ह्नासदाहलत्वा॥ क्वाथयित्वा पिबेत्क्वाथं॥ कफपित्तज्वरापहं॥ ६७ पिपासाज्वरदाहघ्नः॥ मामघ्नं वह्निदीपनं॥ ६८॥ रसः॥ ॥ शुद्धसू
तं समं गंधं मरिचं टंकणं कणा॥ चत्वारस्तुल्या सिता योज्या॥ मत्स्यपित्तेन भावयेत्॥ ६९ त्रिदिनं मर्दयेत्तत्र॥ रसोयं चंद्रशेखरः॥ १२
छिगुंजं माडिकाद्रावैः पेयं त्री॥ तादकं [illegible] ॥ ७० तक्रभक्तं च दातव्यं॥ पथ्यं तत्र प्रदापयेत्॥ त्रिदिनात्पित्तश्लेष्मोत्थं॥ ज्वरं हयं नां
शयज्वरा॥ ७१॥ इति पित्तश्लेष्मज्वरः॥ [illegible] ॥ इति कायस्थ चामुंडात्मज हरति मिश्र [illegible] ज्वरचिकित्सा नाम षष्ठोध्यायः॥ ६॥ ॥ ६॥ ॥

॥सप्तमः सन्निपातज्वरो ज्वर एको यद्यपीरितः तस्य भेदान् द्वयधिकवहे नानाचार्यानुसारतः॥५॥ निदानं॥ ॥अम्लस्निग्धोष्णतीक्ष्णैः कटुमधुसुरातापसेवाकषायैः कामक्रोधातिरूक्षैर्गुरुतर पिशिताहारसेवादिभिश्च । शोकव्यायामचिंता ग्रहगणवनितात्यंतसंगप्रजावैः॥ आयः ... तिद्वसामह्र ... यर शारद्वर्षेण सन्निपातः॥२॥ अकस्मात्सील विरंति रकस्माद्भुरुत्तमे॥ अकस्मादिंद्रियोत्पत्तिः सन्निपातस्य लक्षणं॥ ३ सन्निपातज्वरे नाडी सर्वज्वरगतिं गता॥ काष्ठकूटस्य चक्राणां॥ विचित्रगतिसंगिनी॥४॥ मंदं मंदं शिथिल ... [illegible] लसितं स्थलं व्याकुलं व्याकुलं वा। स्थित्वा स्थित्वा वहंति धमनी याति नाशं च सूक्ष्मा॥५ नित्यं स्थानात्स्खलति पुनः [illegible] अंगुली संस्पृशेया॥ नाडी रवं बहुविधतरैः सन्निपातासे दशा भ्रा॥६ मूत्र ... रिद्रावर्णी ... [illegible] लसंनिभं मलरूक्ष सितः पीतः विद्धि श्वेवाल्पतिश्रुतं ... [illegible] ... गाश्रुति मुखं स्वादं न जानाति॥ ष्टीवति कफल्लोहितं॥७ जिह्वा ... [illegible] ता॥ राष्टेस्तुद्वेरलपनं मौनं वा क्रंदनं दिवा॥ ... रूपे ॥२ शीतं दाहं ... पि भजौ ... दिकां हंति सान्निपातस्वरारु ... गुसांप्रतं॥ ५ वर्ष नवी पिंडीनस्या हाय निरूढ तस्य वा कफस्थानानुपूर्व्या ... रसे॥ ... जरोगघ्नास्य वह्नेना ... पि द्वयोरपि निग्रिय हाय नादति ... हीनयोर्द्वयासंल ... [illegible] ... त्रयं॥ ... कफस्य ... तत्स्थानां क्रियातत्वदितिज्वर विकित्सितं॥ १ तथा दोषब्रु ... [illegible] ... स्यापा ... नेपातासीवमया॥ योस्त्रधर मानवा॥१

रूयंधिकं। पर्पटः कट्फलैः शुंठीः क्वाथोयंफल्गुकापह ... ॥ इति फल्गुः॥ ॥ हीनमध्याधिकैर्यस्य। वातपित्तकफैः
क्रमात्। स्याद्वैदारिककर्णीयं। सन्निपातस्सुदारुणः॥ ८ अल्पस्थलकटीतादः। मध्यदाहरुजाक्रमाः। ज्वराल्क्रम
शिरोहद्ग्रो। मन्याहृदयवाग्रुजाः॥ ९ प्रमीलकश्वासहिक्काकासचाता। विसंज्ञकः। प्रतिश्याछर्दिराजस्यातं
द्रारुविमार्द्दवं॥ १० प्रथमोत्पन्नमनंत्र। साधयंति कथंचन। तस्मिन्नसंनिविष्टेत्र। कर्णमूलेस्सुदारुणा॥ १
पिडिकाजायतेजंता। र्ययालुप्रेणसिध्यति कृच्छ्रोपर मतस्य। व्यधीमोबंधुकल्पनं॥ १२ कफाधिकसं
निपाते। हृद्त्यादिगणो हि यः। सपंचमूलसंयुक्तः छिन्नाशीरकिरातकैः॥ १३ नायंतपनंताव
न्माह्तं॥ क्वाथस्वष्टावशेषतः॥ सावेदारिकक स्थितं सन्निपातं निकृंतती॥ १४॥ इति वि
दारिककर्णी॥ ॥ ॥ ॥ मध्यहीनाधिकेदोषैः क र्कोटकोतिदारुणः। अंतर्द्दाहोविशोषणा। ब्र
वींतनवत्राकपति। १५ परक्तिमालक्षतानेवालचलतस्य रवमंडलं। यत्नेनाकर्षितस्लेष्मा। हृदयान्नपसी
द्यात॥ १६ इच्छाणावादतंपार्श्वे। उद्घातरवन्याततति। प्रमीलकश्वासहिक्का। वर्द्धतिचदिनेदिने॥ १७ जिव्हादंष्ट्र
परस्पर्शी। गलंश्वाकेरिवाहतः। विसर्ज्जनानि जानाति। क्षुजातचक्षुपीतवत्॥ १८ हृष्ठिवतश्लेष्मणा ग्रसे
श्वकश्चक्लोष्ठतालुकः। तंद्रीनिद्रातियागात्तीहतवाक्शिह्वस्तिष्ठति॥ १९ नश्यतिनजातस्तानि। विपरा
तानिगच्छति। आयस्यातेतरबजरा। सरक्तष्टीवतेस्यग्ना॥ २० दशमूलंबृहत्यादिगणोवर्म्माह्वसंयुतः॥

१७

तः॥ अष्टावशेषं कोष्णो शौ॥ क्वाथः कर्कोटकापहः॥४४॥ इति कर्कोटकः॥ ॥ हृद्गमध्यमहीनैस्तैः संमोहकोतिद
रुणः॥ प्रलापश्वाससंमोहः कंपमूर्छारतिभ्रमाः॥४५॥ कासहिक्काप्रतिश्यायमुखशोषोतिपार्श्वरुक्‌। एकपञ्चा
शिद्यातस्तु। एतद्विशेषणं॥४६॥ दशांघ्रिसषडंगं तु ब्रह्मयामसमन्वितं। क्वाथः संमोहकं हंति सन्निपातं
सुदारुणं॥४७॥ इति संमोहकः॥ ॥ हीनातिहृद्गमध्यैस्तैर्याम्यः स्यात्सन्निपातकः॥ रक्तष्ठीवमनेत्रत्वक्‌
दाहहृल्लासविभ्रमाः॥ अपि हृदयं तथा तच्चास्य हृतस्मी हस्थूलफसः पततेत स्यमूर्द्धधिः॥ श्रय शोणित
मेव च॥४८॥ शीर्षिदंतमस्तकश्च एतद्विशेषणं॥ षडंगस्य गणोयं षष्टी। सित्तादार्वी किराततं॥
शः॥ द्राक्षावासशोनाक। छिन्नारिष्टकपद्मकैः॥ काकाडुंबरिकाकुडा। श्रृंगी। रा। दिषिकटू
फलं॥४९॥ क्वाथः शीतहृतापाया। मधुयुक्त याम्यका पहः॥५०॥ इति याम्यः॥ ॥७॥ ॥ मध्यस्थहृद
हीनेस्थाना म्नायां क्रकचः स्मृतः॥ मोहप्रलापमूर्छास्युः ॥ स्वेदस्तंभशिरायहः॥५१॥ वर्चोनिद्राग्निदौर्बल्यं॥
हृल्लादाहारुचिभ्रमः॥ कासश्वासौ तथा तंद्रा। संज्ञाना शोहृदियहः॥५२॥ स्वेन्योरक्तं विसृजति॥ तत्राप्येत द्वि
शेषणं॥ अवीकि त्रिरात्रान्मृत्युश्च न वत्पेव न संशयः॥५३॥ पंचांग्रसषडंगेंद्रा। पाठा विश्वा विषामृताः॥ वासकंक
कट्फलं द्रौडे। क्वाथोयं क्रकचापहः॥५४॥ इति क्रकचः॥ ॥ स्थहृद्धीनमध्यादाषस्सन्निपातस्तु पाकलः॥ शिरोरु
क्मघश्वासं प्रलापच्छर्दिरोचकाः॥ वैधर्म्य[illegible]नो च ज्वरं वाचा[illegible]मतानां कंपा वदना॥ सिंही व्याघ्री सठी श्रृंगी॥ यु

यासंदशमूलकं । ह्यतो शीरवर्म्मी ह्रिः क्वाथः पाकलकापहः ॥ अथ इतिपाकलः ॥ ॥ समैर्देविषुकं पिलेः कूटपा
कलका निधः त्रयामाणपि दोषाणां ॥ सम्यक्रूपाणि लक्षायते ॥ अश्विंदंडवत्समबला स्तावेवाऽ ग्रिपाद्वत्
या निद्रा रत्नि किंसाया ॥ रूपाण्युक्ता ह्यत्र ॥ ७ तः शर्वैरिव संक्षी ॥ विज्ञेया कूटपाकलः ॥ व्याधित्यो दारुणा
त्यश्चा वज्रस्तत्रा विसंन्निलः ॥ २७ केवलोच्छ्वासपरमस्तब्धो लोचनः त्रिरात्रा परमेश्रजीतो न्नवतीजीविते ॥
तदवस्थं तु वैदश्च ॥ मूढो व्याहरात जनः ॥ धर्षितारा ह्यासे निवानववेलायां चरंतिया ॥ अघवाश्रुवात क
चित्प्रयहिंपाश्रूलरात्रासे ॥ रवपित्रा त्वेगुदिस्कोचे कास्तश्वान्येमस्ताकहतं कुलदेवी चनादीनं ॥
षर्धितं कुलदेवाते ॥ अथ नृह्यच पीडाभपारस कर्ण्येमतिचापर ॥ वदंतिसन्निमातं ॥ त्रि
यजः कूटपाकल ॥ अथ कूटस्थे ज्ञीयातदोषै ॥ बलिनि ॥ कूटपाकलः ॥ निंबविश्वदेवदु ॥ अन्यतिक्ता
कलिंगकैः ॥ अथ गजाक्वादशमूलाष्टैः क्वाथोऽष्टादशांगकः ॥ मत्फकल्पान् वरान्सर्वान् ॥ नरविलान्
सन्निपातकान् ॥ अथ मुस्तादिदारु विस्तंड ॥ प्रलापश्च ममूढता ॥ कासहृद्ग्राहमाश्वानि श्वास हिक्कावमीहरः ॥
७४ ॥ किराताद्यष्टांगः ॥ ॥ शृंगी शठी द्रजवधन्वयासवाद्यपद्मापटोलकटुकादशमूलसिंहाघ्री वाक वा
यकमिमंप्रणहंतिकष्टानष्टादशांगनरविलानपिसंन्निपातान् ॥ अथ शृंगाद्यष्टांगः ॥ ॥ विल्वाश्मान्तदकट
हत्फलद्वरमूलकुडाह्वयं सममिता ॥ अष्टौ ॥ निलारिः ॥ गोमूत्रकटुरूचकहिंगु विडेकृतः क्वाथः सद्यद्

१८

जमयास्यतिसन्निपातं॥४६॥शृंगीनार्यीनयाजाजी।कणान्हनिंबपर्पटैः।देवदारुवचाउष्णायासकट्फलनाग
रैः॥४७॥मुस्ताधान्याक तिक्तेंड।शठीपाठ गदूरणुत्रि। हस्तिपिप्पली चव्यकाग्नि।पिप्पलीमूलजीरकैः॥४८॥निंबार
ग्वधत्रायंती।विशालासोमराजिभिः।विडंगरजनीदार्वी।यवानीभिःसमन्वितैः॥४९॥समांशैः साधितःक्काथ।
हिंग्वाद्रक समन्वितः॥अभिन्यासंज्ञयघोरं हंतितंद्राचितं क्षणात्॥५०॥सन्निपातान्मदारुजान्।त्रयोदश
विधांश्च येत्।कर्कटमूलंचादिकांवामूर्छाचापिविना घतः॥५१॥निद्रानाशंमन्वरोधं।स्तुक्षमंगशिरोग्रहं॥
दाहकासं स्वशमाय।सन्धाशीतन्वरं हटं॥५२॥ छिंष्ठे दप्रशामनं॥शुकाजिका।विशोधनं॥५३॥शृंगादि
॥ ॥कट्फलाष्टवचापाठ।शर्करा।जाजिरा पर्पटैः॥दोवदार्वित्रायाश्शृंगी।कणान्हनिंब
नागरैः॥५४॥नाशीकलिंगकटुका।शठीकट्फल धान्यकैः॥समांशैः साधितःक्काथो।हिंग्वाद्रकर
सैःयुतिः॥५५॥कर्कटमूलोद्भवंरोधं।हंतिमन्यागलाग्र यांन्।कफवातन्वरंश्वासं।कासंहिक्कारुचग्रहं॥
गलगंडुगंडमालां।स्वरभेदं कफात्मकं।शिरोगुरुत्वंबाधिर्य।हृद्दिंचकफामदः॥५६॥दशाम्लाद्युतालेषसंन्निपा
तानिदं तिहि॥५७॥कट्फलादि॥ ॥किरातभूषणनाशी।वचा।कुंत्राशा तावरी।रास्नामृतानताद्रावीं।ब्राह्मीत्रायं
तिकासठी॥५८॥पाठपटोलगो गयो।देवकाष्ट निशाद्वयं।ष्टषोविशाला मंजीष्टा।मोरटातिविषान्वयां॥६०॥
शृंकलिंगारुक्वकः॥शृंगोद्भदारकः॥मोहिनीमज्जालेद्युक्तिः॥क्वाथोयं शंकोमतः॥हतिहंतिशूलवमीहिक्का

31

४०३

संनिपातांस्त्रयोदश श्वासंकासंभ्रमं दमूर्छा। हृज्ज्वरं पार्श्ववेदनां॥ इत्याधेलके त्रारीनामा केरातादिरसोयम॥
॥इति किरातादित्रिंशक॥ ॥त्रायी निंबघनाश्च यामृतलताच्च निंबवासावृषा॥ त्रायती कडुका वचा त्रिक
टुकरणोदन। कत्राक्रमेः॥ रास्ना यासपटोलपाटलिस्ट्हद्दाब्री विशाला निंत्रा॥ ब्राली पुष्कर सिंहिकाद
यसढीक्षव्यद्व देवद्रुमेः॥ इत्युक्तोयं किल संनिपात निवहान्धा त्रिंशादंगः कृणउष्ण्यी निज तेजसा वि
जयतसर्पान्गुरुत्मा निव। किंचिश्वास बलासका सगुदरुक हृद्रोगहिक्कामरुन्मन्यास्तंभगलाम
याहृत्तिमलावस्तंभवधानपि॥ इति त्रायादि त्रिंशकः॥ ॥त्रायुग्राक्षान्य शेर्यं छिनित्रष्ठ
खरी त्रायमाणाद्य तिक्ता। वासाश्रृंगीगुडूची इजकूलकगदः कट्फलेंद्री किरा
तेः॥ त्रायी ठस्पर्शश्रृंगी दश्राजटविजया त्रिवृत्तिः सन्निपातः श्वासखेदो हिंजाड्यभ्रमकसनः त्रि
दाराचकघ्नः कषायः॥ इत्पसद्यादिषडिंशकः॥छ॥ ॥राश्नाश्रृंगी पटोलेंद्र जलकुष्ठ नगद व्यघ्री निंब
तिक्ता॥ ब्राली त्रायी सुराव्हछिन्निशाटषविषाषदकटुस्त्री छिद्रीप्यं गाण्योकुडे हिमेला दश्राजटममृता॥
वेल्लसम्पाकधात्री। त्रायंती हिंगुकोंती यवनजसढीकट्फलेंद्री किरातं॥ इति मूर्वाकें त्रे निकुंभामरुज
रुबनतंद्रोडचंडकषायो। हृद्रोगः श्वाससर्वे क्षयपवनकृजाल्पाग्नि नानामयघ्नं॥ इति रास्नादित्रंशक्षि
कः॥ ॥छिन्नाम्लनिंबश्रृंगी दश्राजटजलदंदारुणं संनिपातां॥ इति चउद्दशांगः॥ ॥त्रायी छिन्नादशांग्रि

२९

[OrderDescription]
,CREATED=20.10.20 11:13
,TRANSFERRED=2020/10/20 at 11:17:34
,PAGES=32
,TYPE=STD
,NAME=S0004208
,Book Name=M-1344-JAVARTIMIRBHASKAR
,ORDER_TEXT=
,[PAGELIST]
,FILE1=00000001.TIF
,FILE2=00000002.TIF
,FILE3=00000003.TIF
,FILE4=00000004.TIF
,FILE5=00000005.TIF
,FILE6=00000006.TIF
,FILE7=00000007.TIF
,FILE8=00000008.TIF
,FILE9=00000009.TIF
,FILE10=00000010.TIF
,FILE11=00000011.TIF
,FILE12=00000012.TIF
,FILE13=00000013.TIF
,FILE14=00000014.TIF
,FILE15=00000015.TIF
,FILE16=00000016.TIF
,FILE17=00000017.TIF
,FILE18=00000018.TIF

FILE19=00000019.TIF
,FILE20=00000020.TIF
,FILE21=00000021.TIF
,FILE22=00000022.TIF
,FILE23=00000023.TIF
,FILE24=00000024.TIF
,FILE25=00000025.TIF
,FILE26=00000026.TIF
,FILE27=00000027.TIF
,FILE28=00000028.TIF
,FILE29=00000029.TIF
,FILE30=00000030.TIF
,FILE31=00000031.TIF
,FILE32=00000032.TIF
,